कारयत् । मन्त्रलक्षणगूढात्मा कार्यसिद्धिश्च जायते ॥ मनसा कार्यं मनसा नष्ट
कुर्याच्चिन्तनं यत्नतः सिध्यमानं वचनं न प्रकाशयायमन्त्रवत् ॥ ५ ॥ ७ ॥ उपकार
गृहीतेन शत्रुणा शत्रुमुद्धरेत् । पादलग्नं करस्थेन कण्टकेनैव कण्टकं ॥ उपका
यातव्यस्य शत्रोर्दयापकारेण कार्यं नाश्यमानं तथैव भवति सा कण्टकनकर्न कण्टकेन
स्वस्थापि मायाभ्यो ज्ञानी पूर्वमुपदासकूनं ॥ ६ ॥ ७ ॥ वृद्धमित्रसुखैर्धन यावत्का
लं विपर्ययः ॥ नाथिवमागतकाले क्रियायुद्धमिवास्मनि ॥ धनविपत्ति भवेत्
स शत्रुरेनसना बुद्धिसंज्ञायमानं धनसमाप्तिरुत्तान बुद्ध्यज्ञायानमृत्युलक्षणः

नाद्य सभाजयधर्मान् ... ज्यासद्धनं ॥ ८ ॥ ७ ॥ ह्रीजिह्वा...
किंलालसः । मधुनं वदति कत्याति लाकार्यं मधुनं प्रियः ॥ जिह्वा ...
लघ्वचनं सत्यायन मरुतं स्वादुवचनं ध्यानमग्नाने स्वाद्वचनं ध्यानप्रवेगा
यामृत्युमानं सत्कुशस्तुले ॥ ९ ॥ ७ ॥ जिह्वाग्रे वसते लक्ष्मीः जिह्वाग्रे मित्र
बान्धवाः ॥ जिह्वाग्रे बन्धनं प्राप्तिः जिह्वाग्रे मरणं ध्रुवं ॥ लक्ष्मीवसतयश्चिं जि
ह्वामित्रबान्धव वसतये जिह्वास बन्धनसम्मूर्जिह्वास मरणं ... जिह्वास ॥
१० ॥ ७ ॥ प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ॥ तस्मात्तदेव वक्तव्यं वचने का दरिद्रता

2012 I

स्त्री

नदनिद्रता ।। प्रियवाक्य ज्ञानन वस समस्त प्राणिवं सन्तुष्ट जुइ । धन न वाक्यन द
रिद्र जुय मज्यव ।। १३ ।। ७ ।। क्षमिदाग लदण्डेन शङ्क पानि ध्वना जहान जुत्रः
दानापदानीव जन्तुन म्लान मनायिन ४ ।। भवान जुव वक्षे यस न कयाछ जुव वक्षे ग
कुन लूपघान याय याछ जुव वक्षे मिम तुस खूय याछ जुव वक्षे पन स्त्री खूय याछ
जुव वक्षे ध्वखू नावकन नन जुव वक्षे खूं काय ।। [illegible] ।। ७ ।। क्षान कायिनमायाक्ष म
पिव दाक पान गं । जिघान क जिघास्मीयात्व मन व्यक्ष लाव न ।। धमूनास क्षू
जुनस नां ब्राह्म नजु न सनां खूं जुन फन ञुव द्वन्दि सव ब्राह्म णमाव कन सनां व्र

क्षादयान मकछ ।। [illegible] ।। ७ ।। नाकुं पालय भनिरयं निरयं धर्म्म पनायन ४ ।। नि
र्जि म ४ पन सेन्मानि पनि धर्म्म णिपालय नू ।। नाजा स्यें नाक्ष याय जुनं धर्म्म स
यन थध्वं न जुप नसनाजय नवजोवि ।। [illegible] ।। ७ ।। पूर्व्वी पूर्व्वी विविन्वियो
मूलक्ष पानकान यन मालाकान क्षूं वांमानि यथाजा नानिस्वान नी ।। नाजाः
याभूक्ष णजुन मलिनीयामृक्ष णर्थ्वं स्वान क्षाक्ष कुछायनव लानथंलावस्थाछ
नमाव कमनव ।। [illegible] ।। ७ ।। कूनि मित्र मूदासिनं मध्य स्थ स्थ विनाजुनू ४ । योन
दुष्ट्वानि मन्यामा सच सर्व्व तन ध्वनि ।। नकुडानकु पन न मित्र डामित्र पनन मः

अस्य सर्वाद्यक्षंडा मध्यस्थन हत्तु नामित्र नाम सन्नधाव ध्वर्ज्ञयासर्व्वकार्य त

द्रक्षयू ॥ [illegible] ॥ ७ ॥ ज्ञनायज्ञस्वयत्कत्वा ज्ञनाथः कन्नद्रप्रियः ॥ [illegible]

रक्षीच नन्नः श्रीपूर्वविन्नध्यानि ॥ मनुष्यस्य ज्ञायमस्तार्थ वयग्राढस [illegible]

दक्षस्त्वाग्रलद्राव नायास निष्ठनी मनिष्ठर्न्नन्नयव्रलद्रावध्वस योकर्म्मः

नुष्यश्रीपुर्न्न नाद्रक्षयू ॥ [illegible] ॥ ७ ॥ कः कालः कानि मित्रानि कादेशः कोव्यया

गमः कस्याहं का च मे शक्ति निति चिन्त्यो मुहुर्मुहुः ॥ कालज्ञ नं सुखि श्ववकाः

कृयः मूढाकृपदूविपथाय ज्ञीमाणाम वाप्यऊज्ञयूवस्य ऊणकि ज्ञाना ज्ञुवालः

पुत्र कि मालस्य सपथ्याहान काह्नक॥ पओम॥ पुजि मानजायओ पुत्र दिनाजिन॥ थानक
अविसर्यं थन कायह्नंल ब्याल थ्व मनव गान्ह स्याह्नन कायमर्ध्य गान्ह मन नमा संसान॥
थ्वनह्नाकूवुयु गान्ह गनसा नाजक जा मम ह्नग्यनी मान्य आयुव दिनयुर्ति मा ह्नमः॥
ह्नन थ्वनाटी॥ २५॥ गुण म्वूकिय नीयह्नं किमानीथे प्राजनं॥ विद्यायक नथ थ्व
रि र्म्भव॥ ह्नीन विवर्जिता॥ गुणमयन्न याह्नन ग्याटजननं ह्नुप्र याजन दहर्म
यमहसाधज्व नकाथ्वायक मूलमवन्न॥ २६॥ ननस्याहन नं नूपं नूपस्याहन
न गुणं गुणस्याहन न ह्नानं ह्नान स्याहनं नह्नमा॥ मनुष्य यात्याहन नह्नन

नूपरव नूपयात्याहर्म्भ ह्नन गुण गुण यात्याहर्म्भ ह्नन ह्नान ह्नान यात्याहर्म्भ ह्ननह्न
मा॥ २७॥ गुणप्रह्न सिमा नूपं शील प्रह्न सिमा कुलं सिद्धि प्र सिमा विद्याह्नाणप्रह्न
सिमाथ्वनं॥ नूपमरव नत गुणन ह्नन कुलमरव ननय शीलन ह्नन विद्यामरव नत
य सिद्धि नह्नन धन मरव नत य हलहागन ह्नन॥ २८॥ गुणस्याहन नूप ह्नल
लस्याह नं कुल॥ सिद्धस्यह्न गाविद्या सुहाग स्याह्न नंथनं॥ गुणम सलदाव नूप
रवं ह्नालह्नन शील म ह्निन दाव कुल रवं ह्नाल ह्ननं सिद्धि ह्नन दाव विद्या रवं ह्नाल
ह्नन दहलुक मदक दाव धन रवं ह्नाल ह्ननं॥ २९॥ गुणह्नायम नूप गालह्न

वायव कुल सिद्धिं हु वायव विद्या शागहु वायव धर्म ॥ नृप यात्मा कर्म रूज्नी गुप्त कुल
यात्मा कर्म रूज्नी शील विद्या यात्मा कर्म रूज्नी सिद्धि वनयात्मा कर्म रूज्नी दु कुकि ॥ २
०॥ सु कुल याउ यन्त व्या, पुत्र विद्या सु याउ यनु ॥ व्यसन याउ यक्व कु मित्र धर्म नि
याउ ज्नु ॥ कन्या याउ नयरूज्न सिंह कुल पुत्र याउ नप विद्या दक्व हगक्व याउ
नपक्व पंवास मित्र याउ नपरूज्नी धर्मस ॥ ३१ ॥ नासु ख्वगि सिनाभनु न्नीति
र्धन सामली ॥ व्यनसा यसकायानी नानियानं मह्ग दघि ४ ॥ उपायया नवाव भनु
पवन वुं उर्व्व मरूव पा माल वुं का हाव मरूव सागन समूद्र वु पन याय जीव ध्वनं

सूर्थन रूनी लोकस्यं उक्वाग याय स्वक्वि उहान मा... ...
दनी काकनं हाव ॥ स्वव स्वंदिव दंकुन्या हाना ध्वयन कर्मस ॥ सुक्वि उहदिन प्र:
सिं लोक स्वकू ना गनक लोमवा पुनग कयादस्कि सुक्वन क्वं ... नगकदिन प्र:
सिं सुक्वि उहा विद्या मन रूजनसनी दानसाय रूजनसनी सिन्ताय नगकरूव ॥ ३२
॥ याउ ना नस कुस्वानि वुजन्या नि पिपालिक ४ । सुगस्व न्वं नत उजि पदमकीन
क्वमि ॥ स्वग मवुस्यं वक्व या सपानिन वालस्कि याउ नवानं पना गमक्व स्यं ध्यान
सा सपानि नं, गजूत लिस्व क उक्वा गयाक सूर्थन ॥ ३४ ॥ गनिन थ्या ४ गनि विद्या गः

नेपर्व्व नमा [illegible] नेर्द्ध म्मं ग्व नामम्व न्वायामम्य गने ४ ग नै ४ ॥ वनना दाय याय वि
यायन पर्व्व नजाय धर्म्मयायज्ञायायथ्व न ढ म्ह्व नाढ न नुदव म्वा गवूय मनवा ॥ ३
ग ॥ गुनुम्हगु यायाविद्या पुम्ह लनवननवा । मूथवा विढ्यविद्या रुनुथनागल ॥
यन ॥ विद्यालायरु नं थ्वप नानकुदव गुनु गुगु नागनीथपूल्वम न थ्वनन विद्या
न विद्याढ लन ॥ ३७ ॥ न काङ्क न ४ थ्वदा नानं वगुनूनाविमनयाम । थ्वनयानि गनं
नथ्वा न्वाअल मृपिजायम ॥ न्हूकनकु ज्ञात यथं ढ म्ह रुनमनागुनूनिन्दायाकः
न्ह गनक्रिमीश्रीयायाथानिमरु न्मकायावन्ति थ्वन्याअल याअंरु रुनमपयिन ॥ ३ ॥

ग न्ही नाथेलथ्वहु [illegible] नाजिम [illegible] मद्वेगाम्ह मनालाकी व्र बलस्ववकड च्याम ॥ न्हवाल:
न्हाम्हन सुधम वगीर [illegible] नवाय ह्व समम्ह न्हन यारदमव नानाग म्हम न्हयाम न
साक म्ही थ्वम्ह लखिवकयाय ॥ ३८ ॥ न्ही ज्ञिनाकान नन्व म्ह व लवान्विय दर्शन ४ ॥ म्ह
मादीमदादन ४ थ्वनीहान ४ मड च्याम ॥ काउयाम्ह नूनू जमव ललवम्ह लाक जगु
व म्हमादीमरु वकिवद्वन थ्वम्ह थ्वमीलानयाय ॥ ३० ॥ मम थं [illegible] नगाम्ह रूम ४ पनि:
मध्य जिनाथ्वम ४ । थे ज्ञोगी थ्वगु [illegible] जम ४ सना थ्वम्हारिधीयम ॥ हम्हाकलासम:
थंगाम्ह म्ह विवद्वन पम्ह ० छिजय [illegible] नजम्ह वधायवम्हगूल गुनवम्ह थ्वम्ह मम्ही

धाय॥६१॥ समस्तरूपगमस्तु रू ४ बाहनं जुनना जिम ४ सोत्यबी थ्यंगु नपजन मूर्ण

थक्वाहिधायगु ॥ समस्त गठंगमस्तु गवथमनेदान यायमव शूल वील गुदवनं

थ्वस्कं शंख्याल धाय ॥ ६२ ॥ मध्यवीवाक दू ४ प्राक्रू ४ पनचिक्वापलक्वक ४ धीनायथ्ये

कवादीच नुसदूभाहिधायगु ॥ मूरव्यक्वानी वचन लजुन लक्वानी पनवाधयाकथी

थ्वहिनकं हंख तुह्राक थ्वस्कं दूनङाय ॥ ६३ ॥ पार्थिवस्य वरु स्यवरु दामिगुनः

लक्ष्मीं जनसवर्द्धन साजा नाछ्रुगा निम्हथ्येवस्त ॥ साजज उक्षवनऊ गुनलदः

नक्वाढात गार्कन साजा सावृद्धिम नसानं शाक्वं रुणतिधाय ॥ ६४ ॥ स्तुनुः

वद्दहीनानी दयां क्रूर्वक्रिसतु दं । आदिमध्यावसानलूनमयासम्हि निक्रियां ॥ ध

सनिश्चय याछन कुलवन्क दयावन्क । हन्तुनियाछन आदिमध्य वसान नां

विक्रियामयाक ॥ ६५ ॥ पन्तिगजुगुना ४ सर्व्व सूर्व्वदाव्वास्तुकनला ४ ॥ तस्मात्सूः

र्व्वसरूपस्य प्राक्रू एकप्रनायगु । गुन समस्त दूविचक्व न रूानीयाकप्रासेस

मस्त दू सूर्व्वयाक थ्व नन सूर्व्वदाल स्त्रिभात न रूानीक्वलेयमाल ॥ ६६ ॥ प्राक्रू

निया क्रमानतु सम्हि नाक्रू स्तुनागुना ४ । यगम्ह निवासथ्व जुक्वलथ्वपनाः

गम ४ ॥ रूानीनसाऊ नया कार्जस साजास स्वमातुन द्वाथिव सङ्गमा हिं जनतम

स्वर्ग्गस प्राप्त जुयु लक्ष्मी वृद्धि जुयु ॥ ७० ॥ मूर्खनियाके मानसु तया नाबा मलीय
त४। मूयगपर्थनाश्वनन्न कपठनकुर्व ॥ मूर्खयाजन याकोर्यस नाजासस्वर्ग्ग
याप नस्वायु जूयजस लक्ष्मीमायू पनतसनन्नकवन्नायिव ॥ ७१ ॥ नस्याङ्कमीत्व
नामार्थ धर्म्मकामार्थवृद्धय। गुणवन्त नियाके गुणहीनं विवर्ज्जयत् ॥ धमन:
मानस्व नाजान धर्म्मसर्थकामवृद्धि यायन गुणवन्तम्ह स्याकेनयमाल गुणहीं:
नपम्ह नाजन ॥ ७२ ॥ यर्क्किञ्चित्कुनुम कयागुरुवायादिवाछुस ॥ गनन सम्बर्द्धनं:
नाजा सूकनर्द्धू छन्नेनपि। गुणवन्तम्ह नयाकनपान धर्म्मन गुरुयाछनसू:

गुरुयाके सूकन याछनंनाजासलक्ष्मीवृद्धि यायु ॥ ७० ॥ यथाक्रमयनीतन
४नापन सन्कदन४। नथा पूनूमसर्व कूलशीलनकर्म्मणा ॥ गर्थ लूया थं कू
सदायशाकर्दनलूयाजनिक्वाया गर्थ मूर्थ्यवूकूलसाज्ञनकर्म्मना पूनूमयायं
नीक्वायाय ॥ ७१ ॥ ऋानबंद्रवनरुम्या वान्नक ब्रासनागमं स्याप त्कालनथामित्
कार्य्यविक्वनव्हेय ॥ उज्ञवनहिनमायरका क्वार्य सर्ज्जनहिनसाय स्यापदाम:
मित्राहिनमायविपत्तिसविमयमद्गनछाव ॥ ७२ ॥ ७ ॥ रुया४नक्वविधो
नाजनूरुमाथममथ्रमा४। जनिपाङ्गाय यथायाग्या मिविंधयञ्ञवकर्म्मसू ॥ ७:

१ नमः रुद्र धा लनं ॥ विरुनिमन्त्रस्य विपवादमबि गायत्रीछन्दः विरुनिध्य
व ऽऽवि विनियोगः ॥ ० ॥ अनूष्टुप्छन्दः कनूअ जदवता रुद्रमनुहिमन्त विनियोग ॥ ० ॥
अग्निनिनि रुद्र बाहु त्रिनिरुद्र जललिनिरुद्र स्थलविनिरुद्र ग्रामनिनिरुद्र
सर्वमन्त्र विदरुद्रमेमानिवक्रु विरुद्राणि ॥ ॥ जप ॥ ॐ ह्रौं ॐ ३ ॥ ॥ कपालस ॥
संरुवनमः ॥ क्रा सनसमिय ॥ ॐ नमः ॥ वायनमः ॥ नूगउस ॥ ब्रक्रालनम ॥ ॥
नकूस ॥ रुद्रवाहनायनम ॥ ॥ कंथूस ॥ रुजायनमः ॥ ॥ जवबालास ॥ यक्ष नमः ॥ ॥
जवलकालस ॥ बूजयनमः ॥ ॥ जवर्कविस ॥ आदित्यायनमः ॥ ॥ खवबालास ॥ बज्राय
मनमः ॥ खवलककालस ॥ बामजवायनमः ॥ ॥ खवर्कविस ॥ पूर्वजनायनम ॥ ॥

दूधीथिस ॥ वहस्यानमः ॥ ॥ मीलखागालस ॥ रुद्रायनमः ॥ ॥ सर्वमायवमाल
ननमः ॥ लाहानसिय ॥ ॐ निविरु निमन्त्रः ॥ ॥

2012 I

[illegible] तिनमा[illegible]द्दिवाव कामिक्षथाम्रनिल्ल धम्रनयनामा [illegible]

[illegible] मीमर्वगा ह्नन नैका [illegible] दिनं नुहंगायुवकामिकनिलपर्वि कुलिम [illegible]

[illegible] नि लाक्ष स[illegible] [illegible] ञ्जपाधककयन मानिवहनयामवादिक

दद्ववरहनवीमा द्दनथ्यानक

देवि ठमानी

अपवनलून गविधि ४ रिग्वमसिंग्व सध्वमथ्व मदूथनथवस । अन्थअस । याउन
प ॥ १३ ॥ थ्वानथ्यं मूर्खन क्वन । गद्वस्य सनि नंगा ४ अस नुष्ठ मरकाछ । लउछ्व यं
ननाधिय ४ ॥ लूलागी । न्हायन व क्राधी कृपि विक्वन सनुष्ठ मरुव । थ थिंग्व उ अवेन ।
नाउानमाउ नमाल ॥ १४ ॥ लउ स्वामिन म सूय । मलू अकजन लउन । कृपना
द विलाेअङ्क । नस्मार्ख कनना गनं ॥ कूनिडप स्वामी नाउ नमाल । ध्वनाेजायाकार्जनं
गङ्ग चू ॥ १५ ॥ वामाेतायामूना मूर्ख ४ थ्र मकावाग्विवानम ४ ॥ निस्नकावन्यूवर्नः
थ्वरार्जीदस्यामलूवं ॥ विपलिसम गवक्री थरून मूर्खकायथरून । क्रायण्छुजिम

याक, मामसां थरुन स्नेहम दू सर्ज्जनं थरुन थ्वनमात नान महाम्हस्व दयु ॥ न उ
॥ न कश्चित् कस्यचिन्मित्रं न कश्चित् कस्यचित् प्रियः । कारणाद् एव जायन्ते मित्राणि रि-
पवस्तथा ॥ मित्र दयु सर्ज्जन दयु कारणेन मित्र गु सर्ज्जन डाग क्रुरयु कारण दः
दनकाव ॥ ११ ॥ कार्य्यार्थी भजते लोकः न लोकः जनमार्थितः । वत्सः क्षीरक्षः
यं दृष्ट्वा परित्यजति मातरं ॥ कार्ज्यया लुनुगलन लोकन रुजनयमाल ग्वथे
माध्यनगम स्वानदूदू आनमदनकाव मासा गातनलं ॥ १२ ॥ कुशाग्रसनिना
निडा मूर्खस्य कस्य कुशानामिः । कृतः सौख्यं दरिद्रस्य दुर्ज्जनस्य कृतः क्षमा ॥ द्व

समस्त नकःवर्क्व याङ्गदमदू कुपि मस्तकवर्क्व याङ्गकिमदू दरिद्रया सुखं मदु
दुर्ज्जनया क्षमा स्वं मदु ॥ १३ ॥ मस्तकस्य कुशानामान्यौ दुर्ज्जनस्य कृतः क्षमा । वि
ष्मात्कीर्णं कृतः स्त्रिया कृतः सत्यञ्च कामिनां ॥ ख्वू याक मानि स्वं मदु दुर्ज्जनया क
क्षमा स्वं मदु वेश्याया स्त्रीत्व स्वं मदु कामियाया सत्य स्वं मदु ॥ १४ ॥ दुर्ब्बलस्य बलं राजाः
जा बालानां रुदितं बलं । बलं मूर्खस्य मौनत्वं चौराणाम् अनृतं बलं ॥ दुर्बलयाव
लकं जुजा बालानकं ख्वयावन रुल ख्वाय मूर्खयाव नकुंच्वनाव मवास्यं चौरान, ख्वुय
वलकःन्तं रुःख्याव ज्वाया ॥ १५ ॥ ए ॥ मूर्खानां धनिनां दरिद्राणां बालवृद्धतपस्विनां

[illegible]या यथनि [illegible] मर्व[illegible]धिवाङनि ॥ मनि मदुया [illegible]सनया खसकय
[illegible] थमस गनि रुनं नाजा मं ॥ ८२ ॥ व्याधिनस्यार्थ हीनस्य
[illegible] मस्यच ॥ हृदयाल्मेक दयस्य सदृर्दे गनमीबर्थ ॥ व्याधिनपीतन
पर्श्वंवया [illegible] ल्वाप्वानचांवया कृदयम ल्मेकन दकन पेथांवयाध्वन
याढङाबधी किनजनया मूरवस्यायान ॥ ८३ ॥ ग्रूतु लक्वा सनबाफ दूर्तिढंख
कुविग्रह नाजद्वानमानवा य ४ निस्कजि मवाचन ४ ॥ वायरुनदार्स्य
पदावनवनयमदल शत्रुबविग्रह दनदार्स्य नाजा सक्व दस्ति रुनदार्स्य

मन्मनसथमस विवानयाकर्ण्णतन्यूभय ॥ ८४ ॥ रात्रसुद्धिर्म्मनुष्याणीङ्गा
नथर्मसद्विकर्म्मस रात्रनचूम्विनाकाका रात्रनदुहिमानना ॥ मनुष्ययाङ्कुकः
र्म्मङ्गनसनां सिद्धिरुनं रात्रमात्रनस्त्रीचूम्वनयनं क्वात्रयाध्वालसत्रूम्वनय
नं रात्रनरव ॥ ८५ ॥ नदनविग्रमकाछ पाबाल्नेनयमन्मय रात्रष्ठूविग्रन
दव रुस्माकृानामकृकृनं ॥ लाङ्गंमनिगरामथनमकृतमदू रात्रमात्रनदव
[illegible] ॥ ८६ ॥ डि ष्यालांदनमाचान्याङ्गानमाचार्यदवना
[illegible] ङाम कृल्माजनदवना ॥ डि ष्यायादवगुगुनूगुनूयादवङ्गा